M. T. B. COLLEGE, SURAT

Manuscripts Library

No. Ref.
Ser. 1526

TITLE: Jñan moktikvi Vrata udyapana

1326

Incomplete

: : Janmāṣṭamī Vrata - Title dyāpana

: : : Author

: : : Editor

: : : Year, Vols.

: : : Publisher

1326 : : : Remarks

न्निजग्मद्दहात्। कालियोनामसर्पोयंनिश्चयाद्भक्षयिष्यति। बालकउवाच श्रृणुवार्त्तांमहेःकां
तेयदर्थंवसमागतः। कालियस्यशिरोभ्रूतंकंसद्वारेगुहारितं। कोपमानात्तदासावभर्त्तारंवाक्यमब्रवी
त्। किंशेषेनागभोस्वामिन्नरहेशत्रुःसमागतः। उदतिष्ठन्नागेंद्रोयुयुधेबालकेनसः। मूर्छामिप
तितःकृष्णःसस्मारगरुडंतदा। विहंगराजस्तत्रैवतत्क्षणादागतोहरिं। आरुह्यगरुडंतेननिर्जितःका
लियस्तदा। कालियस्यततःकांताजल्पमानामुहुर्मुहुः। अहमेवंनजानामिकृष्णंत्वांभुवनेश्वरं। र
क्षरक्षमहादेवभर्त्तारंदेहिमेहरे श्रीकृष्णउवाच कंसोनाममहादैत्यःपुरस्तस्यसमर्पिणि। नी
तातत्रभविष्यामिभर्त्तारंतवभोगिनं। सत्यमेतन्मयाप्रोक्तंगछस्वस्वगृहंप्रति। नारदउ॰
प्रस्थितोयमुनामध्यात्सकृष्णःसर्पसंयुतः। कालियस्यतुशब्देनत्रैलोक्यंकंपितंतदा। मथुरान
गरींप्राप्यकंसोयत्रैवतिष्ठति। कमलानितदादत्वापन्नगोमोचितस्तदा। यमुनामध्यमास्थायगतः
सर्पस्तदागृहं। कंसोपिविस्मयाविष्टस्तदाहृद्विस्तृताननः। हर्षयुक्तस्तदाकृष्णआप्यमानस्तुगोकु

के। यशोदा हर्षसंयुक्ता कृष्णं दृष्ट्वा समागतं। तत्संगीतं च वाद्यं च तदाभूद्गोकुले शुभे। हर्षयुक्तास्तदा लो
का आयाते बालके भवन्। इंद्र उ० अक्रूर किं तदा कृष्णश्चरितं तस्य मे वद। न हि तृप्तिर्ममास्त्यस्मिन्श्रु
त्वैव पुनः पुनः। नारद० मथुरायां पुरे रम्ये यमुनाया अदक्षिणे। कंसभ्राता महातेजा चाणूरो ना
मनामतः। मल्लयुद्धसमायातो तेन तुल्यो जनार्दनः। युद्धं प्रवर्तितं शक्र तयोस्तत्रैव मल्लयोः। तुमुलं मु
ष्टिशब्देश्च कंसः केशी निपश्यति। कंठे पादौ तदा दत्वा चाणूरो निहतो युधि। विख्यातश्च तदा केशी
कंसभ्राता च दारुणः। सोप्येवं निहतो दैत्यः संग्रामे केशवेन तु। जनाः शशंसतं कंसं दैत्यं द्वौ निहतौ कृष्णं
दैत्या सति। विषादं च गताः सर्वे लोकास्तस्मिन्हते सति। बालकेन हता दैत्याः किं तु चैतन्महाद्भुतं। कोपेन
महताविष्टः कंसो भ्रष्टतत एव सः। ततः सर्वे महादैत्याः खड्गशक्त्यास्त्रपाणयः। आज्ञां प्राप्य समा
याता युद्धे युद्धविशारदाः। कंस उ० युद्धं कुर्वंतु भो दैत्याः सर्व एव ममाज्ञया। अनेन सह कृ
ष्णेन प्रयाता युद्धकोविदाः। ततस्तं युयुधुः सर्वे शस्त्रास्त्रैर्युद्धदुर्मदाः। कृष्णेन सह वीरास्ते

ततः सस्मार केशवः। गरुडं पूर्वमित्रं च बलदेवं च माधवः। चक्रं सुदर्शनं तद्वत्पूर्वदेहे च माधवः। आयातं च त
था चक्रं गरुडश्च समागतः। आरुह्य गरुडं कृष्णश्चक्रमादाय सत्वरं। केषांचिद्बाहवश्छिन्नाश्छिन्न
ग्रीवास्तथापरे। शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः। विछिन्नजंघास्त्वपरे पेतुरुर्व्यां महा
सुराः। एकशो द्विक्षिचरणाः केचित्तेन द्विधाकृताः। कृष्णेन चक्रहस्तेन बलदेवेन वै हताः। मुसले
न हलेनैव निहताः पतिता भुवि। माघमासे सितपक्षे सप्तम्यां सूर्यवासरे। सूर्योदयस्य वेलायां
मृताः सर्वे सुरास्तदा। श्रीकृष्ण० तिष्ठ तिष्ठ महादैत्य कंस दुष्ट सुदारुण। मद्धस्तनिहतस्त्वं
हि विक्रीडिष्यसि भूतले। इत्युक्त्वा वासुदेवोथ कोपमानो महीतले। शिरोरुहैः समादाय कंसं दै
त्येश्वरं तदा। भ्रामयित्वा शिलायां क्षिप्तो गतासुः सोभवत्तदा। हते कंसे महादैत्ये शंखशब्दस्तदा
ह्यभूत्। लोकाः सर्वे समागत्य वासुदेवमपूजयन्। जयेति देवाश्च मुदा तमूचुः परमेश्वरं। पुष्प
वृष्टिं मुमुचुः सर्वे देवाश्च वसवा सवाः। सहर्षा बलदेवाश्च कृष्णश्च सुमहारथः। नंदगोपस्तदा देवी

देवकी च प्रमोदिता। यशोदा हर्षसंयुक्ता लोकाः सर्वे प्रहर्षिताः। इंद्र उ० ब्रूहि नारद यत्नेन कृष्णजन्मा
ष्टमीव्रतं। किं पुण्यं किं फलं चास्य किमर्थं पूजयेद्धरिं। नारद० भाद्रमासस्य सितपक्षे ह्यष्टम्यां व्रतमाच
रेत्। ब्रह्मचर्येण संयुक्तः स्थापयेत्कलशोपरि। कृष्णरूपं च शेषं च सौवर्णं भक्तिसंयुतः। चंदनं चागु
रुं धूपं पुष्पाणि कमलानि च। वस्त्रेण वेष्टितं कृत्वा पूजयेद्विधिवत्तदा। अभयामानयेत्तत्र गु
डूचिं च सुपिप्पली। धार्यते शुंठिका चैव कृष्णस्याग्रे पृथक् पृथक्। मत्स्यः कूर्मो वराहश्च नारसिं
हाथ वामनः। रामो रामश्च कृष्णश्च बौद्धः कल्की च ते दश। स्थापयेद्दशरूपाणि देवकीं च तथैव च॥
गोपालांश्च यशोदां च पूजयेत्सुसमाहितः। वर्षे वर्षे च संपूर्णे कुर्यादुद्यापनं बुधः। विप्रांश्च पूजये
द्भक्त्या दक्षिणाभोजनादिभिः। यः करोति व्रतं चैव भुक्तिमुक्तिप्रदायकं। आयुः कीर्तिर्यशो लाभं पुत्र
पौत्रादिकं तथा। वर्धते तस्य नित्यं च मृतो मोक्षमवाप्नुयात्॥ इति श्रीभविष्योत्तरपुराणे इंद्रना
रदसंवादे जन्माष्टमीव्रतकथा समाप्ता॥ अथ जयंतीव्रतकथा॥ नारदः जयंत्याश्चैव माहा

त्म्यं कथयस्व पितामह। यत्कृत्वाहं गमिष्यामि तद्विष्णोः परमं पदं॥ ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि प्र
भावं चाष्टमीभवं। अष्टमी पुण्यजननी ह्यष्टमी पापनाशिनी। स्मरणात्कीर्तनान्नृणां सप्तजन्मा
र्जितं मुने। जयंती हरते पापं किं पुनश्चोपवासिता। कृष्णजन्माष्टमी लोके प्रसिद्धा पापनाशिनी। क्रतु
कोटिसमा ह्येषा तीर्थानामयुतैः समा। कपिलागोसहस्रं तु यो ददाति द्विजोत्तम। तत्फलं समवाप्नो
ति जयंत्याः समुपोषणात्। कृष्णाजिनसहस्राणि तिलधेनुशतानि च। दत्वा तत्समवाप्नोति जयं०
ससागरां धरां चैव दत्वा यत्फलमश्नुते तत्फलं समवाप्नोति जयं०। मत्तेभानां सहस्रं तु अश्वानाम
युतं तथा। दत्वा तु यत्फलं प्रोक्तं तत्फलं समुपोषणात्। कन्याकोटिसहस्रेण यत्फलं कविभिः स्मृतं
तत्फलं समवाप्नोति जयंत्याः समु०। वापीकूपसहस्राणि देवतायतनानि च। कृत्वा तत्फलमाप्नोति
ज०। मातापित्रोर्गुरोश्चैव भक्तिमुद्वहणां नृणां। यत्फलं कविभिः प्रोक्तं तत्फलं समु०। गयार्थे ब्राह्म
णार्थे च स्वाम्यर्थे संत्यजेत्तनुं। तत्फलं सप्तगुणितं जयंत्याः स०। आपन्नार्तिहराणां च तीर्थसेवारता
त्मानां। सत्यवादिनियमपुण्यं जयं०। यस्तु वर्षशतं पूर्णमग्निहोत्रं समासते। एकेनैवोपवासेन जयं

सः फलभाग्भवेत्। गयायमुनाचंद्रभागा पुण्या सरस्वती। एतासां श्रवणं पुण्यं तज्जयंत्याउ
पोषणात्। नानाग्निहोत्रिणां चैव यत्फलं समुपोषणात्। तत्फलं समवाप्नोति जयंत्याः समुपोष
णात्। यत्पुण्यं श्राद्धदा ६ हृणां पितृणां च मृतेहनि। तत्फलं समवाप्नोति जयं०। व्रतेनैवोपवा
सेन जागरेण च नारद। अंबरीषेण दाल्भ्येन शुभुमारणागाधिना। सगरेण ककुत्स्थेन दिलीपे
न महात्मना। मांधात्रा त्रिसुहोत्रेण जनकेन तपस्विना। एते चान्ये च राजान्ये धर्मज्ञे सत्यवा
दिभिः। तुष्ट्यर्थं देवकीसूनोर्जयंती समुपोषिता। कृत्वा राज्यं महीं भुक्त्वा प्राप्ताः कीर्तिश्च शाश्व
ती। जयंत्याश्चोपवासेन विष्णोर्देहलयं गताः। वालखिल्यादयो विप्रा वसिष्ठाद्याश्च ये द्विजाः। प्र
कुर्वंति जयंतीं च साधवो मुक्तिसिद्धये। गौतमेन तु गार्ग्येण जामदग्न्येन धीमता। वाल्मीकिना
कृता या च महत्तपविवृद्धये। कृतं रामायणं येन विष्णोश्चरितमुत्तमं। शौनकाद्यैर्महासिद्धैः ऋषि
भिश्च महाधनैः। कृता कर्मविशुद्ध्यर्थं मुक्त्यर्थं मुनिसत्तमपुंगवैः। धर्ममर्थं च कामं च मोक्षार्थं मुनि
पुंगव। ददाति वांछितान्कामान् श्रवणोस्यं ह्यासिताष्टमी। प्राजापत्यर्क्षसंयुक्ता बुधवारेण संयु

ता। वर्षे वर्षे च कर्तव्या तुष्ट्यर्थं चक्रपाणिनः। जन्मार्जितं महापापं प्रहराद्धैर्न लीयते। कृते रात्रौ जागर
णे पापं नश्यति दिहिनां। गीतहास्यविनोदेन निशाग च्छति नारद। पुरतो वासुदेवस्य तस्य विष्णोः प
रंपदं। कोटिजन्मार्जितं पापं ज्ञानतोज्ञानतः कृतं। प्रसादाद्देवकीसूनोः प्रहराद्धैर्न लीयते। शरद्दान्ने
नवयत्पापं यज्ज्ञातं स्मृतकान्नातः। तत्पापं नाशयेद्घोरं जयंती समुपोषणं। गृध्रकाकादिमांसं च भ
क्षितं मुनिपुंगव। येन भुक्तं जेयं स्यात् द्विजश्रेष्ठे बुधवासरे। कृष्णजन्माष्टमी प्राप्ते येन भुक्तं च
नारद। त्रैलोक्यसंभवं पापं भुक्तं तेन न संशयः। जयंतीवासरे प्राप्ते ये कुर्वंति द्विभोजनं। वराव
रवधे पापं तस्य स्याद् द्विजोत्तम। ब्रह्मघ्नश्च सुरापश्च गोवधस्त्रीवधोपि वा। न समो मुनिशार्दू
ल जयंतीविमुखस्य हि। ये कुर्वंति हरेः पूजां जयंत्यां बुधवासरे। सुप्रसन्ना भवेत्तुष्टा देवकी विष्णुना कौ३
सह। व्रतेनाराधयेद्देवं देवकीसहितं हरिं। स प्राप्नोति हरेः स्थानं देवानामपि दुर्लभं। क्रियाहीनस्य
मूर्खस्य परान्नं भुंजतोपि च। न कृतघ्नस्य लोकेस्ति जयंती विमुखस्य च। जन्माष्टमीव्रतं चैव कु

र्वंतीह नरो नमाः। त्यक्त्वा यमपथं घोरं यांति विष्णोः परं पदं। कार्यंति न विप्रेंद्र लक्ष्मीस्तेषां सदास्थि
रा। राजिकं दैविकं वापि भयं वाग्निसमुद्भवं। विफत्वा न भयं रौद्रं मारुतं रोगजं भयं। स्मरणाद्वा
सुदेवस्य मृत्युःकाले न वै मुने। सिध्यंति सर्वकार्याणि कृते कृष्णाष्टमी व्रते। तिष्ठंति सर्वतीर्थानि गृ
हे नित्यं दिवौकसः। देवाय ज्ञाश्च मुनयः सर्वे पुण्य ऋषिको त्रयाः। त पारण्यानि विप्रर्षे मुक्तिस्था
नानियानि च। गृहे तिष्ठं सर्वाणि जयंती व्रतकारके। तस्य सर्वाणि तीर्थानि देहे तिष्ठंति नार
द। यः करोति नरो भक्त्या जयंती कृष्णवल्लभां। स करोति पृथिव्याश्च प्रदक्षिणमनन्यधीः
वर्षे वर्षे च विप्रर्षे क्रियते यस्य मंदिरे। कृष्णाष्टमी सवे मत्यो ज्ञानतया देवतासमः। न वेदैर्न
पुराणैश्च विचार्येदं मया मुने। युतं मन्नाप्यधिकं वापि कृष्णजन्माष्टमी व्रतात्। कृष्णजन्मा
ष्टमी हित्वा योन्यद्व्रतमुपासते। नाप्नोति सुकृतं किंचिदिति शातातपोब्रवीत्। नियम
स्थं नरं दृष्ट्वा कृष्णाष्टम्यां द्विजोत्तम। विवर्णवदनो भूत्वा तिष्ठति पिं माजयेद्यमः। वर्षे वर्षे च या

नारी कृष्णजन्माष्टमी व्रतं। न करोति प्रमादाद्वै सा भवेत्क्रूर राक्षसी। श्रावणस्यासिते पक्षे कृष्णजन्मा
ष्टमी व्रतं। न करोति नरो यस्तु स भवेत्क्रूर राक्षसः। जयंती वासरे प्राप्ते करोत्युदरपूरणं। कुंभीपाकेषु प
च्यते यमदूतैः कलेवरं। यो न मज्जास्य धर्मात्मा जयंती वासरे नरः। घोरं वं नरकं याति यावच्चंद्रदिवाकरौ
। न भोक्तव्यं न भोक्तव्यं जयंत्या बुधवासरे। रटंति च पुराणानि भूयो भूयो महामुने। यस्मिन् गृहे न
लिखितं कृष्णजन्माष्टमी व्रतं। न भवेत्पातकं तस्य इह लोके परत्र च। सर्वदा स सुखी ब्रह्मन्वर्धते कम
ला गृहे। सुहृतं वर्धते तस्य प्रभा तावर्धते कृषिः। भावास्तस्या विशुद्धा स्युः प्रभूता धनसंपदः। कुटुं
बं वर्धते तस्य मोक्षमूर्तं न संशयः। न दुःखं जायते तस्य रोगजं वर्तयेव च। न कलिर्न च कालश्च न च सर्प
भयं मुने। सर्वत्र मंगलं तस्य नास्ति तस्य ह्यमंगलं। उदये वाष्टमी किंचिन्नवमी सकला यदि। भवेच्च बुध
संयुक्ता प्राजापत्यर्क्ष संयुता। अपि वर्षशतैर्वापि लभ्यते मानवैर्भुवि। अष्टमी बुधसंयुक्ता स
ऋक्षा महामुने। कर्त्तव्या मुनिभिः सर्वैः सर्वपापनिकृंतनी। आचारं श्रद्धया युक्तं तत्फलं शतसंख्यया।

यत्पापं लभते नृणां विना चोरेण वर्जितां। तत्पापं शतसाहस्रं जयंतीविमुखस्य च। ये दृष्टे विष्णुभक्तानां य
दिच्छापरयोषितां। सेवने भवेत्तत्पापं जयंतीविमुखस्य हि। यत्र विष्णुकथा दिव्या पर्व्वते मुनिसत्तम। सु
दूरमपि गंतव्यं यत्र भागवतोत्तमः। अशक्ते गमने तस्मिन् ब्रह्मविष्णुकथास्वपि। जयंत्याः सेवनं कार्यं व
र्षे वर्षे च नारद। कलौ वैतरणी नाम जयंती भवतारिणी। पुरा कृता देवगणैर्मुनिभिर्यक्षकिन्नरैः। पिशा
चोरगगंधर्वैर्ऋषिभिः सत्यवादिभिः। सर्वाभिर्ऋषिपत्नीभिः कुमारैरपि नादरात्। गंधर्वयक्षपत्नीभि
र्नागपत्नीभिरेव च। मनुष्यैर्नरश्चाप्यासि धर्मकामार्थवांछिभिः। त्रेतायां द्वापरे चैव कृते कलियुगे तथा।
कृता सम्यग्विधानेन जयंती पापनाशिनी। ममाज्ञया कुरुष्व त्वं यथाशक्ति भवेद्ध्रुवं। नारदः। तात
केन विधानेन कर्तव्या पुण्यवर्धिनी। कथयस्व सुरश्रेष्ठ जयंती येन तुष्यति। एतद्विधानं मंत्रं च ब्रूहि मे
त्रिदशेश्वर। ब्रह्मोवाच। सनत्कुमारेण पुरा हरिश्चंद्राय धीमते। कथितं मुनिशार्दूल तत्ते वक्ष्याम्यभि
सुव्रत। गृहीत्वा नियमं पूर्वं दंतधावनपूर्वकं। नियमात्फलमाप्नोति न श्रेयो नियमं विना। अद्य

स्थित्वा निराहारः श्वोभूते परमेश्वर। भोक्ष्यामि पुंडरीकाक्ष अस्मिन् जन्माष्टमीव्रते। उपोषितस्ततो मध्याह्ने
स्नात्वा कृष्णतिलैः शुचिः। धात्रीफलयुतश्चैव महाफलविवृद्धये। कृत्वा माध्याह्निकं कर्म स्थापयेद्व्रणं
घटं। पंचरत्नसमोपेतं पवित्रोदकपूरितं। सुधूपवासितं शुद्धं पुष्पमालाविभूषितं। तस्योपरि न्यसेत्ता
चं ताम्रजं वाथ वैणवं। पश्चाद्धेममयं देवं देवकीसहितं हरिं। ददाति माता पुत्रस्य स्तन्यं वै विस्मितानन
ना। क्षीरादिस्नपनं तस्याः कुंकुमादिविलेपनं। कृत्वा कर्पूरपुष्पैश्च मुक्ताहारैश्च सुंदरं। अन्यैर्नाना
विधैः पुष्पैः करवीरैः सितासितैः। पूजयेज्जगतामीशं यथाविभवसारतः। कूष्मांडैर्नारिकेलैश्च खर्
जूरैर्दाडिमैस्तथा। चूतकैश्च समुद्भूतैः फलैरंभासमुद्भवैः। तत्कालसंभवैर्दिव्यैः फलैर्नानाविधै
र्मुने। नैवेद्यैर्विविधैः शुद्धैर्घृतपक्वैरनेकधा। दीपांश्च दापयेद्भक्त्या तथा कुसुममंडपे। गीतं वाद्यं
नृत्यं च कारयेद्यदि शक्तिमान्। शांतिपाठं शास्त्रपाठं गीतापाठं तृतीयकं। सहस्रनामपठनं गजें
द्रस्य च मोक्षणं। यत्तस्य विष्णोश्चरितं पठनीयं पुनः पुनः। जागरे पद्मनाभस्य पुराणश्रवणं नरः। सप्त

जन्मकृतं पापं दहते तत्क्षणाच्छिवत्। एवं कृत्वा विधानेन यथाविभवसारतः। गुरुं संपूजयित्वा तु वस्त्रा
लंकारभूषणैः। श्राद्धदाने तथा होमे प्रायश्चित्ते व्रतेषु च। ॐ वित्तशाठ्यं न कुर्वीत अन्यधर्मप्रयोज
ने। एतेषु देवताकार्ये वित्तशाठ्यं करोति च। सर्वधर्मविनिर्मुक्तो नरके स निमज्जति। धर्ममर्थं च का
मं च यदिच्छेदात्मनो हितं। दद्याच्छक्तितो न्नं गां महीं वै कांचनं तथा। शय्या धान्यं पादुके च भूष
णं वाहनं तथा। देवक्याः प्रसवे काले जाते कृष्णे जगत्पतौ। एवं संपूज्य गोविंदं पौणोस्वर्णमयेथवा। क्षितं
ततस्तु दापयेदर्घ्यं मिंदावुदयमागते। कृष्णाय प्रथमं दद्याद्देवकीसहिताय च। दध्यक्षतसमायुक्तं
कृत्वा तु लसिसंयुतं। कृष्णाय परया भक्त्या शंखे कृत्वा विधानतः। अर्घ्यं दद्याद्द्विजश्रेष्ठ तस्य
पुण्यफलं शृणु। यो दद्यात्सकलां पृथ्वीं ससागरनगान्वितां। अर्घ्यदानेन तत्पुण्यं लभते मान
वः शुचिः। ततो जागरणं कार्यं गीतवादित्रनिःस्वनैः। हरिवंशकथालापैस्तथा भागवतस्य च। य
त्र विष्णुकथा दिव्या श्रूयते कृष्णवासरे। तत्र जागरणं कार्यमन्यथा पापभाग्भवेत्। विना वै धर्म

शास्त्रेण न बोधो जायते नृणां। अबोधाद्धावते धर्मांस्ततो याति यमालयं। तस्मात्सर्वप्रयत्नेन धर्मश्रवण
माश्रयेत्। ततः प्रभातसमये विमले सूर्यमंडले। कृत्वा स्वाह्निकं कर्म भक्त्या परमया युतः। कुंभं च वस्त्र
युगलं प्रतिमां दक्षिणान्वितां। व्रते परे शतात्रेव सर्वं दद्यात्सधेनु हि। ब्राह्मणान्भोजयेत्पश्चाद्व्रतस्य
परिपूर्तये। बंधुभिः सह भुंजीत शेषान्नं तु सदा व्रती। एवं कृते व्रते ब्रह्मन्सर्वान्कामानवाप्नुयात्॥ इ
ति श्रीभविष्ये जयंतीव्रतकथा समाप्ता॥ ॥अथोद्यापनं॥ ब्रह्मोवाच॥ शृणु वत्स प्रवक्ष्यामि
व्रतस्योद्यापनं शुभं। अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर। भोक्ष्यामि पुंडरीकाक्ष अस्मिन्ज
न्माष्टमीव्रते। नियममंत्रः॥ उपोषितस्तु मध्याह्ने स्नात्वा कृष्णतिलैः शुचिः। धात्रीफलयुतैश्चैव स्न
हाफलविवर्ज्ये। कृत्वा माध्याह्निकं कर्म स्थापयेत्कलशं दृढं। पंचरत्नसमायुक्तं पवित्रोदकपूरितं।
सुधूपवासितं शुद्धं पुष्पमालाविराजितं। तस्योपरि न्यसेत्पात्रं वैणवं वाथ ताम्रजं। पश्चाद्धेमम
यं देवं देवकीसहितं मुने। ददामाता पुत्रस्य स्तन्यं वै विस्मितानना। क्षीरादिस्नपनं तस्याः कुंकुमादिवि

त्वात्रभोगान्विविधानुपैतिपदं हि विष्णोः परमांश्च लोकान् ॥ ॥इति [illegible] जन्माष्टमीव्रतोद्या
पनं संपूर्णं ॥ ॥